DPN 6852

Title : चण्ड महारोषण / CAṆḌA MAHĀROṢAṆA

Run. No. 7577 | Cat. No. | Micro. No.

Subject Karmakāṇḍa | Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt.- New. / Maith.- New. / New.- Nep. /

Size in cms. 12X6.5 | Folios 19 | Lines (in a page) 5

Compl. / Incompl. | Chapt. / act /

Author / translator

Scribe / donor पूर्णकाजी ताम्राकार

Date: NS / SS / VS / KS

Ruler / place

Script : New. / Dev. / Bhuj. / Ran. /

Illus. :

Material : palmleaf / paper / thyasaphu /

Condition : fine / damaged by worms, rats, water / one side yellow

Beginning, colophon, post-colophon :

ॐ नमः श्रीचण्डमहारोषणाय ।। ॐ आः श्रीमत वज्र सत गुरुवरश्चरणाकमलाय ज्ञानाव भासन कराय नमः हूँ ॥

चण्ड महारोषण

ॐ नमः … ॐ नमः श्रीवसुमहाचार्यबन्धाय
॥ ॐ आः श्रीमनवज्रसत्वगुरुबुद्धबन्धवनकमला
य, स…त्वज्ञानावतारसनकचायनमः हूँ ॥ मयं:
यनजगत्त्रयावलमिदं माहात्म्य

ॐ नमः श्रीवसुमहाचार्यबन्धाय ॥ ॐ आः श्रीमन
वज्रसत्वगुरुबुद्धबन्धवनकमलाय सर्वसत्वज्ञानाव
तारसनकचायनमः हूँ ॥ मय्यय न जगत्त्रयावलमि
दं माहात्म्यकाचादयं प्रज्ञोपायविलासतारकचक्रे
चक्रः समुद्दीपितं । कल्याणवसुसत्माधिमाद्युपम्:

यं श्रीवज्रसत्त्वस्वयं सायंसत्त्व सर्वसाधनायजगतिश्व:
कृग्रत्तनिष्कषि ॥ॐ ह्रीः विशुद्धधर्म्मसर्व्वपापानि
चाम्य विनाशय सर्व्वविकल्पानयनयहूं ॥मूलक्रोध
न ॥ॐ ह्रीः स्वाहा ॥वज्रा ॥ॐ वज्रमहाचाषघमम
वज्ररस्त्तरमहाक्रोधहूं ख्रतिरस्थाटयरहूं

रुद्र स्वाहा हूं रुद्र ॥लं स्वनमोस्तसहाय ॐ यथा
दिजो नमोत्रमहोपिनासर्व्वनथागगनथाहं हूं
यायिषामिशुद्धन्तु दिव्यनवाविधा ॐ आः सर्व्व
थागगनत्रिषकसमयिय हूं ॥लं स्वकायं रुक
क्रोधन ॥दक्षिण लक्ष आकाश नसूर्य्यमण्डलं

वामहस्तेअः कायमध्यवज्रमस्तुलं ॥ अङ्गुलियाया
सन्यास ॥ ॐ वूँ ऊँ ङिँ ध्वँ हूँ ॥ वामस ॥ ॐ लौँ माँ याँ नौँ वँ
॥ हा ० जा यय ॥ ॐ वज्रमभ्रदस्तादृ ॥ मूलमन्त्रन ॥ श्री
स्वाधिष्ठान ॥ ॐ यन्तु × ॥ थनयूजारन ॥ अधिष्ठा:
न ॥ ॐ वज्रमहाप्रायमसर्व्वविघ्नान्नूत्सायय हूँ ॥ व

लिसलं ध्वगय ॥ ॐ अकारोमुखं सर्व्वधर्म्मानामाद्य:
नूत्पन्नत्वा ॐ आः हूँ फट् स्वाहा ॥ मन्त्र पात्र शोधन ॥
ॐ हः हा: ङ्री: अ: ध्वँ स्वाहा ॥ क्रोधन ॥ ॐ अमृत
रअमृतसंरव ॥ अमृतंयुवमयहूँ ॥ लँ ध्वनमनापि
सहाय ॥ ॐ सर्व्वविघ्नान्नुत्सारय हूँ ॥ वमनवीजा अ

वचाय सत्वायिस। ॐ वज्रलस्वमूलस्व सर्व्वतथागः
ताधिपति ष्कुस्वाहा॥ थन ध्यानमुद्रा॥ अथ लिनि
द्रि सज्जानुसच्चदस्कु पूर्ववर्श, विदितवकनसूर्व्वात
क्कीसीनक्कयात्मः निविदघनगत्रीवच्छुसूत्रा।
सुयक्तः समयतुरवविघ्नविघ्नदक्तोक्कलाय॥

नूकावज्रोसच्चगत्रुत्त्र, वकावक्षायूपायकं। यत्रु
पायेकयाजगत, लकावंसूस्वलकुन्मान॥ कथेवाः
वलमाख्यावं, सर्वबुद्धेसु भेविकं॥ तस्याधिष्ठि
तिगत्न्यमायवसाक्कलंपूवलाद्दकावंकुर्व्यात॥
जवनसक्कजाघ्वालावयाय। ॐ नमः सर्व्वासोयचियूव

केभ्यः सर्व्वतथागतेभ्यः सर्व्वथा ॐ हनरस्मावयर
सर्व्वतत्र नहा नमोस्तु हूँ हूं॥ स्वबनयाभजाद
लावयाय॥ ॐ गृह्ण रक्षरक्ष सर्व्वदुष्टान्याभन व
न्धय महासत्यतधर्म्मतत्त्वाक्षा॥ निर्व्विघ्नवरा
चय॥ थनत्रिकायाधिष्ठान॥ ॐ आः हूँ ॥ आकन

नुय॥ ॐ वज्रमहायावमम वज्ररक्ष हूँ हूं॥ थनञ्ज
सचय॥ ॐ आः वज्रासन हूं॥ ॐ ह्रीं नमभवज्र हूं॥ ॐ या
गमवज्र हूं॥ ॐ आत्मा नमभवज्र हूं॥ नदनू मैत्रीकरु
मुदितायथा॥ चतुर्ब्रह्मविहाराभावयतु॥ आः
कर्षण॥ ० ॥ स्वहृदयपद्मचन्द्रादित्यस्थनीलहूँका

चालयन्तं वह्निं कुण्डलिनां गर्भे संध्या ध्यात्रिगुण
नमयित्वा पश्चात् कनिष्ठं यावत्। गत्वा वह्निकर्णी च
तु महाभाषणमानीयपूर्वानन्तरसिंहद्वारे वह्नि
पूर्वादिद्वयनाविरावः॥ ॐ वज्राङ्कुशमाकर्षय
जः॥ ॐ वज्रपाशप्रवेशय हूँ॥ ॐ वज्रस्फोट बन्ध

यवं॥ ॐ वज्रावेशय होः॥ ॐ श्रीवज्रमहाभाष
णरुद्राचक्रसंगणयविद्याधरवसल्काचायया
घार्घं आचमनं ओं कुमनं प्रतिच्छ स्वाहा॥ अधिष्ठान॥
॥ॐ श्रीवज्रमहाभाषणरुद्राचक्रसयविद्यावसहित
आगच्छ रत्नमण्डलअधिष्ठानकुरु हूँ रुद्रः॥

स्वाहा॥ थमस्थानपाय॥ ॐ युधमहाचाषलवजयू
र्षांप्रतिछ हूं स्वहा॥ ॐ कूष्माचलवजयूर्षांप्रतिछ
हूं स्वहा॥ ॐ धषवजीवजयूर्षांप्रतिछ हूं स्वहा॥ ॐ
गाचलवजयूर्षांप्रतीछ हूं स्वहा॥ ॐ पीगाचलवज
यूर्षांप्रतिछ हूं स्वहा॥ ॐ चक्राचलवजयूर्षांप्रति

स्वह २

छ हूं स्वहा॥ ॐ श्मामाचलवजयूर्षांप्रतिछ हूं स्वहा॥
ॐ भीरुवजीवजयूर्षांप्रतिछ हूं॥ ॐ पिशुनवजीव
जयूर्षांप्रतीछ हूं स्वहा॥ ॐ नागवजीयजयूर्षांप्रतिछ हूं
स्वहा॥ ॐ श्रीर्षावजीवजयूर्षांप्रतिछ हूं स्वहा॥ ॐ
ज्ञायस्वाहा॥ ॐ यमायस्वा॥ ॐ वरुणायस्वाहा॥ ॐ कुवः

नायस्वाहा। ॐ भूम्याय स्वाहा। ॐ सोमाय स्वाहा। ॐ वा
युवे स्वाहा। ॐ श्रीगणनाय स्वाहा। ॐ ब्रह्मणेभ्ये स्वा
हा। ॐ सूर्याग्रहाधिपतये स्वाहा। ॐ चन्द्रानक्षत्राग्र
हाधिपतये स्वाहा। ॐ भूधरपृथिव्यै स्वाहा। ॐ नाग
येः स्वाहा। ॐ जम्बूनयः स्वाहा। ॐ सर्वदिग्पाला:

कपालश्च स्वाहा॥ ॥ॐ वज्रपुष्पे स्वाहा॥ ॐ वज्र
गन्धे स्वाहा॥ ॐ वज्रधूपे स्वाहा॥ ॐ वज्रदीपे स्वाहा॥
ॐ वज्रनैवेद्य स्वाहा॥ ॥लास्या॥ ॐ वज्रवीणे हूँ॥
ॐ वज्रवंशे त्रां॥ ॐ वज्रमृदङ्गे ह्रीं॥ ॐ वज्रमुरजे अः
ॐ वज्रलास्ये हूँ॥ ॐ वज्रमाले त्रां॥ ॐ वज्रगीते ह्रीं॥ ॐ व

ज्रनृत्ये जः ॐ वज्रपुष्पे हूं ॐ वज्रधूपे आं ॐ वज्रालो
किनी ह्रीं ॐ गन्धवज्रे जः ॐ वज्रादर्शे होः हूं ॐ वस्व
ज्रा ॐ स्पर्शवज्री ॐ धर्मधातुगर्भे जः॥ ॥ॐ हूं
स्वाहा वज्र ॐ हाः स्वाहा घन्टा × ॥स्तुति॥ कृष्णाचलन
मास्तुत्यं सुविशुद्धात्मकं विदुं । अक्षयवज्री नमास्तुत्यं

ज्रग... ब्धविशुद्धय ॥ श्वेताचल नमास्तुत्यं ज्ञा
दर्शात्मकरूपकं । मादवज्री नमस्यामि ज्रगत्ते
विशुद्धय । पीताचल नमास्तुत्यं समताज्ञानात्मकं
विदुं । पिशुनवज्री नमस्तुत्यं ज्रगत्त्रिशुनमाक
य ॥ रक्ताचल नमास्तुत्यं प्रत्यवज्ञाविन विदुं ॥

20
15
10
5
0 cmts. 5 10 15 20 25

ॐ नमो भगवति विशुद्धसर्व॥ भगवती नमो नमः॥ अमा
वल नमस्यामि॥ कल्यानुस्मान नूयक॥ जगदीर्घ्या
विशुद्धि स्त्र॥ श्रीर्घ्यावती नमो नमः॥ विघ्नराज
दिनगमश्चुलगमा हूं कानवीजाहृकं॥ द्रष्टालिं
र्यवयीतिकाधवमलंधावाहूलासायवं॥ ॐ ह्वाम

सिविवाजिदत्रिक्षकवंयास्मक्ष सद्वगवं॥ वध्वः
श्रीवनवस्तुयाषमनमसाक्रोधंमूवाहृसया॥ ॥
नर्येन॥ ॐ क्रों ह्रीं क्रीं वस्तुनय॥ वठ २ सुवठ २ कदर
ग्रस्तून २ ग्रस्तुनय २ दून २ यस २ वंध २ जूस्तूय
२ स्तूस्तूय २ मारुय २ सर्वगास्तूमां॥ मूमवन्धनंकु

नूरसर्वताकिनीनां ग्रहदुष्टन पिशाचब्रह्माधिय:
कार्णां ग्राग्रयरमयरमायय रनूनू वज्रवूक, न
क्र रमां वज्रमहासन, सर्व्वमाक्रमयामि, ॐ वज्रम
हाचायवह्रीं हूं हूं॥ ॥थनन्यास॥ पादयो ॐ
यं। गिवसि। ॐ कं स्कन्धे। ॐ वं। नाभि। ॐ ढं म

ध्ये ॐ नं। अंगुल्यां ॐ यं। मूर्ध्नि ॐ यां। सर्व्वावसवक
र्ह्मो ॐ मं॥ थनजाप॥ ।सकृत्यसवज्राधिय× ७
पा यूर्यन्यास, यं ला, घं, स्कु, न, ॥ वलिसलंबनस्य॥
लावना॥ गतयंकाश्वयवायूमण्डलायपि, वंजाता
ल्मो ॐ आः हूं जा न, मूहुवायकन, त्रूलिक्षायायविस्ठी

॥ आः कारनिषण्णं॥ शुक्लयमराजऽनं॥ यचियूपिन
॥ वूँ ऊँ डिँ ध्वँ ह्रूँ॥ लाँ माँ याँ नाँ वँ ज्ञाना॥ गह्वीजाधिष्ठि
तं॥ यावद्धकलरक्तादिकं॥ यचामृत॥ यक्षकृयद्वीयनूय
ननिषण्णं॥ ॐ आः हूँ॥ वलिअधिष्ठान॥ ॥आ
॥ यू॥ यँ॥ ला॥ घं॥ म्रु॥ रा॥ ॥गमाआलिकालियचि

ह्नुग॥ चन्द्रसूर्य्यस्वरावकनूद्धयाक्षहूँकावंदक्ष
॥ ॐ शून्याच्यानुगतासर्व्वधर्म्मा॥ यनस्यवानुप्रविष्टा
सर्व्वधर्म्मा॥ शून्यक्तानुप्रविष्टाः सर्व्वधर्म्माःस्वभाः
प्रमार्द्दसमयप्रमार्द्धं॥ तद्दूक्तवाचयनन्तुमानं॥ व्री
नमस्यनरवयूचेतांःस्वभ्याममानुत्रहद्दकुरदना

ः हूं स्वाहा। गुह्यसिद्धानां शिरायः। ओं वज्रांवचिङः
हूं वँ हाँ ह्रूं वसुमदायाः बलसमयह्रीं द्यष्यडः ह्रीः ॥
स्वान, ज्ञा कलंश, बलि। ओं नमो भगवत्ये श्री वसुम
त्याय धान्याय, रूपवालीनमनुमाग्रा गनकवाय सक
लमातृ विनाशनकवाय, जगसिकसुमवयूषः
वल १

वलमकू ठगिवस, ओं दवलिं गृह्ण २ हन २ वसुमा
ताभिवानय २ धान २ धाम २ छिन्द २ भिन्द २ नाशय २
कारय २ धाव २ हूद २ हद २ दुष्ट सत्वा मम विघ्न
विलकारू भिंकू, हूं २ ह्रूं ह्रूं २ हट् २ स्वाहा ॥ यंवाय
लाय पूजा, लाय्या घंक्षा वाद्यस्तुति ॥

आ हृ २

ह्रैं यथा हि ज्ञानसमा त्रेन सर्वापि नासर्वं तथाग
त तथाहं स्थापयिष्यामि ॥ अघ तु दिव्यैनवाः
मिना ॥ ॐ सर्वगत थगतज्ञानेश्वा कैसमञ्जिय
हां ॥ ॐ शरीरबिंकं म स्ताव स्ति स्पद्मकुवं म हुः
श्रीतं इ पश्चा कंप ज नाथा य स्म क नवंवं

गां ४ ब्रजमानि ॐ हूं
मं स्व वा ॥ ॐ सर्वतथागतमहासमकुन प्रीत
ह्रुं स्वा हा ॥ ॐ वज्रधमन स्वत्रि ज्वरी बिंच हूं
हूं ठा ॥ ॐ वज्र वज्रानि ज्वरी बिंच हूं हूं ठा ॥
ॐ वज्रवाज्र ज्वरी बिंच हूं हूं ठा ॥ ॐ धर्म्मव
ज्वरी बिंच वज्र हूं ठा ॥ ॐ कर्म्मवज्र ज्वरी

क८२

बिंब्रुआजेघार्तिबिकाव्रुमसिवर्ध्ववज्रा
रीषाः॥ दंत्सर्वेपघलंपिंञ्छवत्वांसन्ध
मीावज्राधिपतिवासूरीखेंबामातिबुन
ङममयवंस्ता ४।ऽ वज्रघं थज्रज्र ४।ऽ
वज्रसत्वत्वामरीबिवामि. वज्रनामारीः

थ्यकन्न ४।। हश्रीकिसाञ्जेन मौनोवार्य्य
वंश्रुं वस्त ४।। नभापन्तुया याच्छुछ॥